CHUNILAL GANDHI VIDYABHAVAN
SURAT.

Manuscripts Library
SJ.P.13
Coll. No. 430

Title (a) Surya stotra (b) Arya pūjā

CHUNILAL GANDHI VIDYABHAVAN, SURAT

Shastri Dinmanishankar Pustak-Bhandara

No.: 430. Subject: Stotra

Title: (a) Surya stotra (b) Anga pūjā

Author: — Scribe: —

Date of the work: — Date of the Ms.: —

Place of the work: — Place of the Ms.: —

Size: 6.1" by 3.6" Extent: 9 foll.

Language: Sanskrit Script: Devanāgarī

Remarks:

॥श्रीगणेशायनमः॥ अथसूर्यस्तोत्रंलिख्यते॥ ॥
॥श्रीशिवउवाच॥ अधुनादेविवक्ष्यामिस्तोत्रमं
त्रनिरूपणं॥ पंचम्यांगमयंतत्वंसर्वायिनारणं
धृवं॥१॥ अष्टसिद्धिमयंसाध्यंसिद्धिदंबुद्धिव
र्द्धनं॥ सर्वामयप्रशमनंतेजोबलविवर्द्धनं॥२॥
महादारिद्रहरणंपुत्रपौत्रप्रदंशिवे॥ भोगा
पवर्गदंलोकेरहस्यंममपार्वति॥३॥ स्तोत्रस्या

स्यमहादेविऋषिर्ब्रह्मासमीरितः॥गायत्रीछंद
इत्युक्तंदेवतासवितास्मृतः॥४॥बीजंचयोममा
ख्यातंमायाशक्तिरितीरिता॥प्रणवःकीलकं
देविविश्वंदिग्बंधनंततः॥५॥भोगापवर्गसिध्य १
र्थंविनियोगःप्रकीर्तितः॥दैदीप्यमानमुकुटंम
णिमंडनमंडितं॥६॥विस्फुरात्लिंगितंध्यात्वा।
स्तोत्रमेतदुदीरयेत्॥ ॥कल्पांतात्मककोटि।

भास्करमुखंसिंदूरधूलीजपावर्णरत्नकिरी
टिनंदिनयनंश्वेताब्जमध्यासिनं॥नानाभूष
णभूषितंस्मितमुखंरक्तांबरंचिन्मयंसूर्यंस्व
र्णसरोजरत्नकलशंदोर्भ्यांदधानंभजे॥७॥वे
दाद्यंनादबिंदुस्फुरितशशिकलालंकृतंमू
लमंत्रंयोध्यायेदविद्यादिधनविरहितो।
नाढ्यःपूर्णेंदिरिंदुःसद्यःसंक्लेशपापैर्व

लमुकुटललमद्भुननीराजितांघ्रिर्वाणीशंनीयते
द्राक्षरसदधिसुधापूजितानिस्रवाभिः॥८॥
शिवाकारंवक्त्रिंशशिधरकलाबिंदुललितं वि
भोध्यायेच्चित्तेमनुमुकुटरत्नंनपतियः॥ससंस्या २
मेजित्वासकलरिपुसंघानमचिराद्भवेत्संत्रा
डूमोव्रजतिद्रुपरसुरस्तवपदं॥९॥योमानला
स्तुठमितिस्मरेद्योदह्राहिबिंदुचक्रलाभिरा

मंद्याद्यादिपद्यामृतवर्षिणीवाग्वक्त्रेविनोतस्यकु
रेस्तिनाश्रीः॥१०॥शांकिंनक्तियुनोयदिमनसिजंमध्ये
स्मरंभास्कररोगाद्योनिजशक्तिकामरसिकोद्दा
लारसेनालसः॥वीरावीयमयोनिरामयवपुः
भुक्तेऽभुक्तावयंस्वर्गस्त्रीजनवीज्जितंसभगवा
न्धामावृयंयास्यति॥११॥सूर्येयोस्यनिधार
णियजपतेयोदेविसूर्योदयेमूकःशोकयुनोम

ज्ञानयमयोद्दारिद्रपीडाकुलः॥सद्योगद्यसुपद्युसा
रमरत्नानिर्यातिवाणीमुखान्नस्या रोतनोर्नुवीतिभ
गवान्वश्यासदासंपदः॥१२॥विश्वंविश्वमनोविल
--गतंयोमानसेसंजपेद्यात्रोकामकलासमादि ३
ततनुःकामातुरःकौतुकी॥कामंद्रंतुतिलोत्तमा
तमतमाकामान्निरामासमासद्यस्तस्यवशाभवि
ष्यतिमहातेजस्विनोमानिनः॥१३॥मणिमुकुट

मरीचिःस्फातभाषष्टपाटंकनककलशादिर्याज्ञो
जहस्तारविंदं॥निखिलनिगमगम्यंविस्फुराद्विंगि
तांगेमनसिरहसिन्येष्टंसूर्यमीशंनमामि॥१४॥नू
गेहशोभिनपुरारणनूषितेष्टपत्रां॥चितात्मनवको
णसुराथविंदो॥दिवैनिखिलमरुणांसुसहस्त्रभा
स्वद्दृक्वंभजामिभगवंतमनंतमाद्यं॥१५॥इतिस्तोत्रं
मंत्रात्मकमखिलतंत्रोद्भूतमिदंपठेत्प्रातःस्ना

नोमि हरिः भुवनेशस्य महतः॥ नवैद्याणी वमोविनव

सहितः कीर्तिसहितः परं त्वांतेविस्नोर्वजेतपर

मंधामसवित्रः॥१६॥ इतीदं देवपंचांगं देवदेव

स्य भास्वतः॥ तवस्नेहान्मयाख्यातं नाख्येयय

स्य कस्य चित॥१७॥ तज्ज्ञदेवर्ततेपुण्यंपंचांगंपरमा ४

त्मनः॥ सविभुः सर्वदेवस्यरहस्यंगुह्यमुत्तमं॥१८॥

तज्ज्ञहेनिश्चलाव्लक्ष्मीर्दासीववसतीचरेत्॥ना

वर्तिकायुक्तंगो घृतेनसमन्वितं॥ दीपं

गृहाणदेवेशत्रैलोक्यतिमिरापह॥

दीपं॥ पायसं घृतसंयुक्तंनानाप

क्वान्नसंयुतं॥ नैवेद्यंचमयादत्तंशी

तिंकुरुनगत्पते॥ नैवेद्यं॥ आचमं

॥ कर्पूरवासितं तोयंमंदाकिन्याःस

मारुतं॥ आचम्यतांजगन्नाथमयाद
त्तंहिभक्तितः॥ आचमनं॥ मलयाच
लसंभूतंकर्पूरेणसमन्वितं॥ करोद्व
र्तनकंचारुगृह्यतांजगतःपते॥ करो ५
द्वर्तनकं॥ इदंफलंमयादेवस्थापितं
पुरतस्तव॥ तेनमेसफलावाप्तिर्भवेज्ज

न्मनिजन्मनि॥ फलं॥ एलालवंगक
र्पूरखदिरादिपुगीफलं॥ नागवल्लीद
लैर्युक्तंतांबूलंप्रतिगृह्यतां॥ तांबूलं
॥ दक्षिणाकांचनीदेवस्थापिताचत
वाग्रतः॥ गृहाणसुमुखोभूत्वाप्रभाक
रनमोस्तुते॥ दक्षिणां॥ यानिकानिच

पापानि०॥ प्रदक्षिणा॥ ताम्रपात्रे
स्थितं तोयं फलपुष्पसमन्वितं॥ गृ
ह्णार्घ्यं मया दत्तं सर्वकामप्रदो भ ६
व॥ विशेषार्घ्यं०॥ पंचवर्त्तिपंचदीपै
श्च दीपितासुरसत्तम॥ नीराजनं गृ
हाणेदं सर्वसौख्यकरो भव॥ नीराज

नं॥ नमः पंकजहस्ताय नमः पंकज
मालिने॥ नमः पंकजनेत्राय भास्क
राय नमो नमः॥ नमस्कारः॥ तंदुलैः
पूरितं पात्रं हिरण्येन समन्वितं॥ रक्त
वस्त्रयुगं चैव ब्राह्मणाय निवेदयेत्
॥ वायनं॥ यस्योदये स्याज्जगतः प्र

बोधोयः कर्मसाक्षी भुवनस्य गोप्ता ॥ क
ष्टादिकव्याधिविनाशको यो स भास्क
रो मे दुरितं निहन्यात् ॥ इति ॥ ८
अथांगपूजा ॥ मित्राय नमः पादौ पूज
यामि ॥ रवये० जंघे पू० ॥ सूर्याय० जानु
नी पू० ॥ खगाय० ऊरू० ॥ पूष्णे० गुह्यं०

८

हिरण्यगर्भाय० कटिं० ॥ मरीचये० ना
भिं० ॥ आदित्याय० जठरं० ॥ सवि
त्रे० हृदयं० ॥ अर्काय० स्तनौ० ॥ भा
स्कराय० कंठं० ॥ अर्यम्णे० स्कंधौ०
दिवाकराय० हस्तौ० ॥ अहः कराय०
मुखं० ॥ ब्रध्ने० नासिकां० ॥ जगदेकच

ह्रुषे० नेत्रे०। सवित्रे० कर्णौ०॥ त्रिगु
णात्मधारिणे० ललाटं०॥ विरंचिना
रायणशंकरात्मने० शिरः पूजया
मि॥ तिमिरनाशिने० सर्वांगं पूजया ६
मि॥ इत्यंगपूजासमाप्ता॥ ॥